M. T. B. COLLEGE, SURAT
Manuscripts Library

No. Ref.
Ser. 497

Title: Kund Martanda

497

कुंडमार्तंड.

:	Kunda Mārtanda	: Title
:	: Govinda Daivagna Kavi.	: Author
:	:	: Editor
:	:	: Year, Vols.
:	:	: Publisher
497 :	:	: Remarks

497

Knud Marstrand

कुं·मा· श्रीगणेशायनमः॥ श्रीगुरुभ्योनमः॥ श्रीसरस्वत्यैनमः॥ ॥ प्रथमंगणपतीष्टदेवता
१ स्मरणार्थमालिनीवृत्तं॥ ॥ मधुकरवृतगंडस्थलमालीदुखंडंविलसितकरदंडंविघ्ननाशे
कचंडं॥ वितरितबुधषंडंसल्लसत्सूलपिंडंविदलितपुकांडंनौमितंवक्रतुंडं॥ १॥ हृदयकम रि
२ लंमध्येकृष्णपादारविंदंनिजगुरुपदपूजंसंभ्रमात्साधुभक्त्या॥ अभिमतफलदंसंचिंत्यकुंडा
दिसिद्ध्यैकुरुतइहनवीनंकुंडमार्तंडसंज्ञं॥ २॥ अयाशीलरूपंमंगलंशालिन्यातनोति॥
॥ श्रीयावध्यासोदयश्चारुपादेमोह[illegible]ध्वांतस्तोमनाशप्रचंडः॥ नित्यंज्ञानारोग्यदःसवि
तःसन्मार्तंडोयंमंगलंवस्तनोतु॥ ३॥ आद्योग्रचारंप्रकारणमंजुप्राविण्यातनोतिगणिता
नभिज्ञनवकुंडमंडपक्रमसाधानोद्यतविपश्चितांमुदे॥ रचितोधियाकविबुधागुणप्रियाः
परिम्[illegible]स्यसाधुकिलशोधयंतुतं॥ ४॥ अथातोवधस्तादिपरिभाषाकथनार्थंशा श्रीः
र्दूलविक्रीडितस्वगताद्वृत्ते॥ ॥ चैस सत्ववर्गः प्रपदोंगुलिः समपदः मांस्कनरोष्टर्ध्वंदो १
र्यत्तस्येषुलवः ५ करोजिनलव २४ स्तस्यांगुलंवैयवः॥ स्यात्तस्यपलवं८ स्तस्तद्वकलवो८

स्कावालिक्षातथावात्सागुरपूरेणुरत्रगदितास्तत्तुकूजांशाः॥ ८ क्रमात॥ ५॥ रतिरिष्टमुदितः
कृतमुष्टिहस्तएवविबुधैर्विकनिष्ठः॥ स्यादरत्निरितिसूरिभिरुक्ताकुंडमंडपविधौपरिभाषा॥ ६॥
अथमंडपार्थभूमिशोधनविषयेशालिनीवंद्रवंशाशार्दूलविक्रीडितानि॥ श्वेतारक्तापीतवर्णाचकृ
ष्णासपद्रक्तान्नासवामोदयुक्ता॥ भूमिःस्वादुःस्याक्तेदुस्तिक्तकापिकाषायावैविप्रतोयाण
योग्या॥ ७॥ कुंडार्थयत्र्द्विपरिशोधहलवप्रदूमुखाद्यः प्रथमंस्फुटीभवेत॥ वर्गादिवर्णाः कि
लेतद्दिशिमध्यतःशल्यंमुनीड्दिपयेस्तुमध्यतः॥ ८॥ बुधैर्हंधरणीसमानंकृत्वास्त्वादिनेद्वैः पुरापुण्या
हके मंडं धरां पूणि प तिं सं प्र न्य पु ण्या हि भिः॥ संशुद्धे दिवसे तिथौ च भ युज्ञो विप्रोप के द्ध प्र
गे प्राची सा ध न मि ष्ट मं ड प कृते कुर्या द्वि प श्चि न्मुदा॥ ९॥ ॥ अथ प्राची साधनार्थं वृ
त्तं भुजंगप्रयातवृत्ते॥ ॥ दिशाकेल १२ मितांगुलप्रमितेनकर्कटेनप्रगे गुणेनभुविना
वरविलिख्य मंडलेयात्रिके॥ न वांगुल ९ मितेन रखदिरकंकरेतोद्भवं यष्टाकं केनलक्षणं
ललितेनमत्र संस्थापय॥ ॥ शरद्भ्यांगुलो १५॥ मोधि ७ संख्याभिरनेसमस्तष्टशीर्षशा
लोकोलमाभिः॥ विशेष्वकुभायत्रयस्यात्रयायात्केमांसःपयोनोधस्तत्रामकोष्ठ॥ ११॥

अथप्राचीचालनेद्रुतविलंबितेंद्रवज्रावृत्ते॥ वृषभकर्कमृगालियुयुक्कन्याद्विमितयाघटकेसरिभज्र
य॥तरणितोतिदिशांहरिस्थितोधनुषिनोमिथुनेचविचाल्यते॥१२॥ घटकात्मकंचालनमुक्तमत्रस्थिर
समंयद्दिवसंक्रमेषुस्वल्पांतरत्वान्नकृतंमयान्यन्नातोभवेत्तत्किलदूषणाय॥१३॥ अथदक्षिणोत्तर
साधनेशार्दूलविक्रीडितंवृत्तं॥ द्युनसार्धसमन्वितोन्नतमगुणंमध्यांकयाशान्वितंप्राचीपश्चिम
शंकुयुग्मनिहितंविद्धंकुरुत्वंसुदा॥ धृत्वाकर्णयसूत्ररवंडविलसत्स्थिरेकरेणोत्तरांयामीतश्च
वंद्ययोरविरतंकाष्ठेभवेतांस्फुटे॥१४॥ अथरात्रौप्राचीसाधनार्थंशार्दूलविक्रीडितंवृत्तं॥ मध्येछिद्र
युतांनवीननलिकांसत्सूत्रसंभ्रामितांरंध्रप्रोतगुणाग्रयुग्मविलसल्लंबांनिशायांकृतां॥ कृत्वा
संस्थितएवनक्रनलिकारंध्रस्थदृष्ट्यापुरः प्राचीपश्चिमसाधनंश्रवणतःपुष्याच्चकुर्यात्स्फु
टं॥१५॥ अथचित्रास्वातीवेधप्रकारेशार्दूलवृत्तं॥ दृष्ट्वासाचित्राविलोकयेद्धिनलिकामूलेक्य
रंध्रान्मरुत्तोड्रिस्वात्यनेनलिकाग्रानिलमित्तिर्यक्स्थयसंतरात्॥ लंबाग्रंप्रपतेद्यतश्चनलिकाम्रू
लैक्यमध्यांकतः पश्चात्तःपुरुहूतपाशिहरितोतल्लक्ष्मयुग्मेक्रमात्॥१६॥ अथमंडपार्थचतुर
स्रसाधनेवसंततिलकावृत्तं॥ सूत्रंदिगंतकरशंकुगतंद्विपाशंकृत्वांतलक्ष्मनिजविस्तृतितुल्य

मस्रे॥ दृष्ट्याप्रकर्षयगुणमन्वितिवेदकोणस्याकुंडमंडपविधौचतुरस्रभूमिः॥१७॥ अथमंडप
स्थापनेपृथ्वीवृत्तं॥ ॥परांकुरुकरेणवाकरदलेनचारून्नतांजनाश्रयकृतेकृतावपरमंडपा
श्चैनदा॥ जनाश्रयमितांपरांमरवविधिज्ञमध्येमितांविहायकुरुतान्परान्नयनसुंदरान्मं
डपान्॥१८॥ अथमंडपप्रमाणेमंजुभाषिणीवृत्तं॥ अथमोदिग्१०र्क१२करमंडपक्रतौ
तरणी१२द्व१४हस्ततुलितश्चमध्यतः॥ धृति१८भूप१६हस्तविततोमहान्भवेन्नख२०हस्त
मंडपकरस्तकलार्पणे॥१९॥ नख२०भूप१६सूर्य१२दश१०हस्तमंडपोद्विजतोबुधैर्निगदितेथि
वावरः॥ अथमान्वयस्यवसुहस्त८मंडपःकरिदृक्करौ२८गुरुतरःस्मृतःपरे॥२०॥ अ
थद्वारप्रमाणवेदीप्रमाणकथनेस्पोद्धतावृत्तं॥ द्वाश्चतुष्क४मुदितंदिगंतराहस्तयुग्ममि
त२मध्यमध्ययोः॥ वर्धितंगजयुगांगुलैस्ततद्वेदिकात्रिलवतःकरोन्नता॥२१॥ अथतुला
प्रदानेवेदीविशेषार्थमोपछंदसिकवृत्तं॥ ॥गदितात्वममध्ययोस्तुलायांशर५हस्ताश
शि१हस्तसंमितोच्चा॥ प्रवरद्विकरा७गिरीशभागयहवेदीरुचिराकृतिस्त्रिवप्रा॥२२॥ ॥

कुं॰ कौ॰
३

अथ मंडपस्तंभसमोच्चाकरणे संस्कारोपणे शार्दूलविक्रीडितं वृत्तं ॥ लोकाधारसमत्रिभागकचतुश्चिह्नेषु
पूर्वापरयाम्योदक्षु गुणाद्दिवाकर ॥ १२ ॥ समस्तंभान्सचूडान्बुधः ॥ अंतस्तंभचतुष्टयं ४ गजत्रायेः
दद्यात्करांशं ५ क्षितावावपंचाशयान्कृतो कीलान्पा १६ स्तंभाः कृशानोरपाक् ॥ २३ ॥ अथ स्तंभो
परिचालिकानिवेशनप्रमाणे शिखरिणीवृत्तं ॥ निधेयास्तंभानामुपरितनचूडासु वलिकाः कृतो
नाकर्णांत बहिरपि समस्ताः सुसरकाः ॥ प्रतीची पूर्वस्थाय मशशिहरित्स्था श्च वलिकाविधेयाः को
णस्था मधश्च विविधपि ज्ञाः साण्डुमतिना ॥ २४ ॥ अथ मंडपपरिशिखरकरणादौ सिंहोद्धतावृत्तं ॥
मध्यत्रिभागशिखरं रुचिरं विधाय प्रच्छादये च्छुकटैः क्रमुकैः कवंशैः ॥ सद्वारवर्जितजनाश्र
यमेनमत्र स्तंभा न्विचित्रवसनैरपि मंडपस्तान् ॥ २५ ॥ अथ तोरणादिनिवेशने मालिनी भुजं
गप्रयातवृत्ते ॥ शर ५ रस ६ मुनि ७ हस्ते मंडपात्तोरणानि बहिरपि करतः स्युर्यज्ञवृक्षोद्भ
वानि ॥ अधमसमवरेषु स्याद्दायतिश्चाद्विहस्ता २ चरणदल ६ ॥ १२ विरच्यासांगयस्त्रप्रसि राम
द्धे ॥ २६ ॥ वटोदुंबराश्वत्थवृक्षाधिराजे विधेयानि तानी द्वृदिक्रः क्रमेण ॥ वलैस २
या

क्षि॰

अथ ज्ञांगपक्षीरूपद्धिस्त्विमान्येकके नैववेषामभावे ॥ २७ ॥ अथ तोरणोपरिफलकनिवेशनादौ प्रहर्षिणी भु
जंगप्रयातवृत्ते ॥ स्तंभाधनिमितस्फलकं कुरुघ्नतिर्यक् नर्त्स्वीर्षनव ९ शिव ११ विश्व १३ पर्वकीलान् ॥
आत्मीया द्विलवततांस्त्रिशूलरूपानत्तद्रोपाद्वि २ गुण ३ युगां ४ गुलानि शोवे ॥ २८ ॥ दश १० द्वादशे १२
द्वांगुलाः १४ काष्ठकीलास्त्रि ३ वेदा ४ क्ष ५ तुल्यांगुलं तत्त्रशोपः ॥ पयोजारिकौमोदपैकी माविकाप्रव
धूरमाक्रांतपक्षेक्र तुङ्ग ॥ २९ ॥ अथ मंडपशोभाकरणे पंचचामरवृत्तं ॥ फलालिराजितच्छदालसत्क
दल्यधिष्ठितप्रसून्नगुच्छसंयुतं विधेहि मंडपश्रिये ॥ सुवर्णमौक्तिकोज्वलद्वितानरंजितांतरप्रबंध
दर्पणस्फुरन्मनोज्ञपंचचामरं ॥ ३० ॥ अथ ध्वजप्रमाणादौ पृथ्वीवृत्तं ॥ सुपीतशोणमेचकान्विधाय
नीलपांडुरासितावदातपांडुरांध्वजानृदिरहस्तविस्तृतान् ॥ दिगीशवाहनान्वितान्खचंद्र १० हस्तवंश
केऽपयत्क हस्त ५ संमितान्विधेहि पूर्वतः क्रमात् ॥ ३१ ॥ अथ पताकाप्रमाणादौ भुजंगप्रयातोपं
समवृत्ते ॥ हरित्त्वाभिपचास्यवर्णाः पताकास्तता हस्तत ३ समहस्ते ७ श्चदीर्घाः ॥ विचित्रं ध्वजं
दिक्करं १० दिक्करांशे १० त्रिहस्ता ३ यतं भांतचंदं सुवंशे ॥ ३२ ॥ विधिदानवमौष्ठभापताकापुरुहू ११
तैरादिगंतरानि धेया ॥ नन्वयादीपपरवतुः पताकापरिसंस्थं विधिवन्मुद्गाविपश्चित् ॥ ३३ ॥ अ
थ नवकुंडविधाने कुंडस्थानकल्पना पंचमधरावृत्तं ॥ वेदास्रं याम्यनिकुंडशशिदलममलं वह्निको

स्कन्तंषट्कोणं

कुं॰ मा॰ णेपद्मकुंडंगजभुजमभितः पर्वतः स्युः क्रमेण ॥ वृत्तंवावेदकोणंसुरपतिशिवयोर्मध्यमागे चवेद्याश्चिंशांद्रि ३०
श्वांगुलैर्वीरविभि ११ रिहसमस्तानिकुंडानियज्ञे ॥ ३७ ॥ अथपंचकुंडीविधानेक कुंडपक्षयोः स्थानानि
यमकल्पनेषुअंगप्रयातवृत्तं ॥ हरिभ्रांशुकुंडैर्मवेत्सं चकुंडीयदेकंतदापाशि चंद्रेशदिक्षु ॥ क्रतुनेन
कार्यस्वबुध्यासमस्तंविदित्वामनोवांछितंकर्तुरेव ॥ ३५ ॥ अथद्विजादीनांकुंडनियमानिखिलानि
यमकुंडपक्षकल्पनेस्रग्धराशार्दूलविक्रीडितवृत्ते ॥ ॥ वेदास्त्रं वृत्तकुंडंशशिदलमनलाख्यद्विजा
न्मुख्यमुक्तंसर्वेषांवेदकोणंमखविधिनिपुणप्रोक्तनेवानिरुक्तं ॥ आकृर्वृत्तानिचान्यक्षितिसु
खसुखतोयेषितांयज्ञविधौ द्धिः प्रोक्तंसद्योनिकुंडंसकलमुनिमतंसर्वकार्यार्थसिद्ध्यै ॥ ३६ ॥
श्रीसिद्ध्यैचतुरस्रकेसुतसुखंयोनौदलेमंगलंत्र्यस्रेशत्रुविनाशनंसुखचयोवृत्तेंगकोणेक्रे ४
तो ॥ स्याद्विष्टापहतिः सुवृष्टिरमलेपद्मेष्टकोणेशुभंप्राचीशांपुदिगंतगेजयधनंवृत्तेग्निकोण
विधा ॥ ३७ ॥ अथहवनेकुंडमानकल्पनार्थंस्रग्धरास्रग्विणीवृत्ते ॥ ॥ दिग्भि १० र्वेश्मि ८ स्तको
टौनपकरी १६ मपरेषट्करं ६ पंक्तिलक्षेलक्षेस्याद्द्वे ४ हस्तंसदयुतहवनेहस्तयुग्मं २ सहस्रे ॥ ह
स्त ३ श्चारत्निकुंडंशतमितहवनेरत्निकुंडंशतार्धेलक्षाद्धस्तैकवृध्द्यादशकरमुदितंपंक्तिल
क्षांतमन्ये ॥ ३८ ॥ अर्धकोटौककुप् लक्षहोमे १० खद्वकू ८ लक्ष २० लक्षार्धयोः प्रोक्तनेः स्र कुं॰ ७

६

रिभिः ॥ शैल ७ बाण ५ द्विप ६ द्वंकि २ हस्तोन्मितंकुंडमत्रोदितंसप्तलंनौक्रमा
त् ॥ ३९ ॥ अथकुंडमापनांगुलादिव्यासप्रमाणकल्पनार्थंस्रग्धरावृ
त्तं ॥ ॥ अंगुल्यो वेदपक्षा २४ निगमकृतभुजः ३४ क्ष्माकृता ४१ अष्ट
वेदा ४८ रामाक्षा ५३ नागबाणा ५८ दहनरोसभमिताः ६३ षड्रसाः ६६
पक्षशैलाः ७२ ॥ वेदास्त्रबाणशैलाः ७५ शयतद्दहयवाव्योम० शू
न्यं० शराः ५ खं० पंचा ५ गं ६ नीर ४ मद्रि ७ र्गगन० मगमि
ताः ७ पंक्तिहस्तांतमुक्ताः ॥ ४० ॥ ॥ अथसर्व
कुंडानांयोनेर्दिङ्नियमंशिखरिण्याह ॥ ॥ त्रयाणां

कुं॰मा॰ कुंडानां यमदिशि बुधैर्योनिरुद्दिता सदा सौम्यायैं द्यादतरयोः कुं-
५ डानि तु मते॥ प्रतीच्यां तद्योनिर्भवति मुखमैन्द्र्यां दिशि मखे ने कोणे
योनिः स्याद्द्विजवर न योनावियमपि॥ ४३ ॥ अथ
कुंडसाधने व्यासांगुलादिकथने इंद्रवज्रावृत्तं॥ यो ५
१रूपहस्तावधिहस्ततः स्याद्व्यासः स हस्तात्मक एव कल्प्यः
॥ अत्रांगुलं एवमतो यवः स्याद्यूका ततः स्यात्क्रमतोंऽकसं
ख्या॥ ॥ ४२ ॥ ॥ ॥

नु
अथ चतुरस्रसाधने शार्दूलविक्रीडितं वृत्तं सद्व्यासं द्विगुणं द्विधा गृहसहितं तत्तु र्यो शाचिह्नान्वितं प्राचीपश्चिमशंकुगं सु
मतिना कलातत्तः कोणयोः॥ धृत्वा तत्करतः शशांकदहरितं व्याकृष्य चिह्नं न्यतो यामीं वांछितसिद्धिदं कृतिभुजं कुंडं भवे
दिंद्रादिक ४२ अथ योनिकुंडसाधने धृर्तवृत्तं यूकायुग्म २ समेतभूयव १ युतैः पंचां ५ गुले स्वेनतः क्षेत्रं वर्धय
चंद्रखंडयुगलं २ कर्णोद्भिमानाङ्क्लिख॥ पश्चात्स्वगुणद्वयेन पुरतो कार्यो निकुंडं स्फुटं सलुत्र प्रदमुत्सु सछविपुतं स्या
द्धक्षिदिक्संस्थितं ४४ अथार्धचंद्रकुंडसाधने धृर्तवृत्तं नंदसमां १९ गुलके धरा १ यवयुक्के १ युः ५ लि
क्षान्वितैर्वृत्तार्द्धं गुणतो थवा भवति यत्कर्कटके न द्विज्ञ॥ प्रसंचां कुरुतत्पुरः शशिदलं मांगल्यपुष्टिप्रदं धर्मा चारि
तमुलुसच्छविपुतं श्रीसप्ततंतो मतं ४५ अथ त्र्यस्रकुंडसाधने इंद्रवज्रावृत्तं स्वाभीष्टके दस्रपुराग जांगुलं ८ श्री
व्योध्वसंवर्ध्य रसां ६ गुलं गुणं॥ श्रोण्यं तलः सूत्रयुगं पुरोंकगं दद्दिच्छिकोणां रघुनाशादं भवेत् ४६ अथ वृत्तकुं
डसाधने इंद्रवज्रावृत्तं विश्वांगुले १३ वेद ४ यवैर्द्विर्यूका २ पंचा ५ न्वितैः सत्कुरु वृत्तकुंडं॥ शांतिप्रदं विषमपादि
योग्यं प्रोक्तं मुनींद्रैः सलिलाद्रिदिक्स्थं ४७ अथाष्टकलिकषडस्रिकुंडसाधने शार्दूलविक्रीडितवृत्तं इत्येषा
दशानि १० भुवा १ मुनि ७ भुजै २ रिंद्रार्द्रगाः षड्गुणान् ६ कुल्यान्वेविधृतेतदुन्मितगुणैर्दलैकंकंपोस्य वा॥ ॥ता
न्संध्यंगकृजानुधृतिंचसकलां संमार्जये यद्वद्वैलाम्यग्वोत्कलिकंषडस्रमनिला शारुडं स्मृतिछेदकं ४८
अथ समभुजषडस्रिसाधने शालिनीवृत्तं शक्रे १४ स्वे ७ लोचनाभ्यां २ विदध्याद् त्तं तस्मिंश्च विक्रषट्कंस
मानं॥ दद्याद्दाह्यं षट्समान्वेंदुदिक्को याता शारुडं स्यात्षडस्रं रिपुघ्नं ४९ अथ पद्मकुंडसाधने शार्दूलशा
लिनीवृत्तं स्याद्वामैः ३ प्रथमां द्वितीयमरिभि ६ स्तानीयकं भानुभिः १२ शक्रे १४ सप्तभि ७ रष्टिभि ३ श्च
चरमं वृत्तं नृपांकांकितं॥ धृत्वादिक् विदिशोः शरांतरमपांकृत्कर्टिकं वोर्ध्वतः प्रचाल्य पष्ट कुरु क्षपापतिहार

कुंडं कुर्यात् सदिशं ५० स्वल्पांभोजाख्यकर्णिकापूर्वेरत्ने युग्मे रत्नेकेसराः षोडशास्युः मध्ये हि स्यात्कर्णिकासत्कसुखं पद्मं कुंडं साधु सर्वं खनित्वा
कुं मार्तंड ५१ अथाष्टास्रिकुंडसाधने शार्दूलवृत्तं धृसा ॥ ५ पंचभिः परिकुना विरचिते हस्ते विदध्यात्प्रागप्रांतरचि कृतो वरः गुणा
न्तुल्यान् रामकांतरे तेषामध्यष्टगुणान् करेण च रत्निं संमृज्य सम्यग्भवेद्दृष्टास्युः कलिकं त्रिलोचन हरित्स्वयं स्कः प्रियरोग्यदं ५२
६ अथ समाष्टभुजसाधने शाकिनीवृत्तं शक्रे १४ द्वीपां वह्निभिः ३ ईशमासिमन्दिग्भिः १० शैले ७ रद्भिः ३२ एभीर्द्रम्यात् दद्यात्तु
त्या नागबाहुस्मारघ्नं कुंडं नागास्रं भवेत् वृद्धिदं कुंडं ५३ अथ पंचास्रकुंडसाधने शार्दूलविक्रीडितवृत्तं बाणेंदुप्रमितांगुले २५ कृतं
यवे ४ बीणे ५ समासारिते हस्ते शरलाभिः २ द्वयेन निगमे ४ वेद हि षु ५ संख्या न जान् तुल्यान् तत्त्व्य शरासि शक्रहरित् कुंडं सवेन्मा
र्जिना हृत्तस्य त्वभिचारशांतिकविधौ सयश्च मन्त्र सर ५४ अथोत्कलिकपंचास्रिकुंडसाधने शार्दूलवृत्तं आकरो २२ भूमि ५
रिंदुना १ श्रुतिमिते ४ हस्ते त्रवेकांतरादुत्कृत्संगुल २५ मार्गणा ५ कित हस्तो दलेषु ५ संख्यान् भुजान् प्राच्यादुत्कलिकं शरा
स्रिवलयं संमृज्य कुंडं कुरु संस्यं त्वभिचारकर्मशमनं पूर्वेहृविद्धसमं तं ५५ अथ सप्तास्रिकुंडसाधने रुक्मिणीवृत्तं इंद्रांगु
लैः १४ कृतियवैः ४ वलयं वतस्मिन् रव्यंगुलैः १२ युगयवैः ४ शरसंख्यकाभिः ५ युक्ताभिरिंद्रहरितो द्विभुजान्विधेहि स्याद्
नदोषरामनेसामसप्तकोणं ५६ अथ कैश्चित्कृतं उत्कलिकसप्तास्रिकुंडं भुजंगप्रयातेनाह नृपैः १६ सागरैः ४ मार्ग
णैः ५ र्हस्तमिंदैः १ गुणैः त्रिवेसप्तनीवाः पुरोकात् निधे हि त्वमेकांतरात् कृतश्रां से श्रवे कुकूलं तुल्यसप्तास्रिकुंडं ५७ ६
अथ खातादिलक्षणकथने समेखलं खातमुशंतियेकेचिद्दृत्रेण तुल्यं त्वपरे विमेखलं वदंति चंद्रांगुल १ तुल्यकंठपक्षो गुकं
वामरवमार्गकोविदाः ५८ अथ खातादिप्रमाणकथने शार्दूलवृत्तं खातार्थे खनमेदिनीमथ रत्नः प्राणेंदुतुल्यांगुलैः १५
कंठार्थं त्वमितसप्तांगुलभुवं १ खेटांगुले ९ श्रोपरि कस ४ ग्नि ३ द्विः २ मितांगुलैस्तु विततास्तुंगास्तथा मेखलास्तिस्रस्युः
गुणलोचन २ क्षिति १ मिताः स्ताः श्रेष्ठमध्याधमाः ५९ अथ पंचमेखलाप्रमाणकथने शार्दूलवृत्तं उच्चार्थाक ९ मिता धां
गुलैस्तदपराशैलैः ७ र्भुवा १ पंचभिः ५ स्तातीर्येषु भिरग्निभिः ३ स्त्रिभि ३ रथान्यावह्निभिः सागरैः ४ शैलै ७ स्तद्वर

माभुवा १ रसमितैः ६ वैदैः स्तता ४ सागरैः ४ श्चाद्भिः ४ शत्रुभिः ६ रग्निभिः ३ स्वयरसैः ६ श्चैश्रैरथाकैः १२ क्रमात् ६० अथ पद्माकारना
भिकरणं शार्दूलवृत्तेनाह पूर्वेना ब्धिभिः ४ रद्रिभिः ७ शुभरत्निः साकर्णिकास्यात्ततः क्षिप्ता १ ङ्केनरसैः ६ र्द्वितीयस्तवो स्युः केस
राः षोडश १६ वंद्रेणांगमितैः ६ शरैः ५ स्तत्रतो कुर्वष्टपर्णान्यसो नाभिः पद्मनिभो बुधेन कथितः कुंडानुरूपोथवा ६१ अथ योनि
लक्षणं पूर्ववृत्तेनाह वाश्वत्थदलसंनिभांतरवपायोविस्ततोर्ध्वं स्थितां द्वादशांगुलयुतां त्रिनांशपरिधिर्विधित्कृत्यैवोन्नता निम्नं कुं
डमिता त्रिनांशमुखतो व्यासार्धदीर्घा मता मूलाच्छिद्रयुतामनाकरुचिरा योनिर्गुणांशगा यता ६२ अथ सर्वकुंडानां नाभि
प्रमाणमेकमेखलाप्रमाणं चपथ्यावक्रेणाह द्व्यंगुलोच्छ्रासमृता नाभिर्विस्तता चतुरंगुलैः यदेकामेखला कार्या षडंगुल
ततोन्नता ६३ अथ मतांतरेण त्रिमेखलाप्रकारं तत्र योनिमानं च शार्दूलविक्रीडितेनाह वेदर्क्षप्रमितांगुलोन्नततता कंठ्यो
द्वियोनिस्तद्दीर्घा बाण ५ भ्रांगुलैः २५ स्तु विततापूर्वेंदुतुल्यांगुलैः तिस्रः स्युः श्रुति संमितांगुलतता स्तुंगाश्च सर्वा बुधैस्ताः
कुंडाकृतयो धरांगुलमिता कंठा द्वहिः शासिताः ६४ अथोक्तिपृष्ठरूतं तद्वावरत्नपन्नपथ्या वक्रेणाह अथवा मेखला
युग्मं मेखलात्रितयं पुनः मेखलापंचकं चैवात्स्यमध्योत्तमं क्रमात् ६५ अथाल्पहवने कुंडकरणाशक्तौ स्थंडिल
करणं मालिनीवृत्तेनाह कनकरुचिरकांता सन्मृदा स्थंडिलं वा करमितचतुरस्रं कूर्मपृष्ठोन्नतं च बुधकुरुतत्तु
ल्यैरंगुलैरुन्नतं वांगुलमितमपि रम्यं स्वल्पहोमे मुदा त्वं ६६ अथ ग्रंथकर्ता स्वजनकाभिधानादिकं स्वग्रंथप्रयोजनं
तरंच शार्दूलविक्रीडितेनाह श्रीमज्जैनरपत्तने शिवगिरेरासन्नसंस्थे सदा यः श्रीकृष्णरतो गदाधरस्तानाथ्यप्रसूत्यो
ऽभवत् तत्सूनुर्गणकाग्रणीर्विमलधीर्गोविंदसंज्ञः कृती लीलावान्करोदमुं स्फुरस्कं ग्रंथं विपश्चिन्मुदे ६७ अथ
ग्रंथसमाप्तौ शाकादि मालिनीवृत्तेनाह गुणशशी रसचंद्रैः १६३१ संमिते शाककाले सहसिबहुलपक्षे कामतिथ्यां
शशांके विबुधगुरुकवीनां दर्पदीपं स्फुटार्थः समगमदतिपूर्तिं कुंडमार्तंडसंज्ञः ६८ अथ ग्रंथार्थयोविपश्चितां स्फुग
मः दुर्बुद्धीनां दुर्गमदतीं द्रवज्रयाह वेदार्थगर्भा गिरा विधियान्हि तेषां ग्रंथाशयः स्फुटमतरो विशति ये मुग्धबुद्ध्या प्रविसंति

कुं॰ मार्त॰ तेषांस्यादिंद्रवज्राहतपक्षतुल्यः ॥६९॥ अथग्रंथस्यसकलवृत्तसंख्यांमालिनीवृत्तेनाह ॥ ॥
६ नवरसमितवृत्तैर्युक्तिसंभ्रमाद्यः पठतिभुविभवेत्सज्ञानवान्विश्ववंद्यः ॥ स्फुतधनस्फरव
संपूत्कामपूर्णोपकामैरीबुधकुलकमलेंदुः कुंडमार्तंडमेन ॥७०॥ ॥इतिश्रीमज्जुन्न
रपुनिवासिगोविंददैवज्ञकविविरचितः कुंडमार्तंडः समाप्तिमवाप ॥श्रीः॥श्रीः॥श्रीः॥

६